Shri Raghunatha Temple MSS. Library,
JAMMU

No. १०८४-घ

Title सप्तमठाम्नायिकम्

Author श्रीशंकराचार्यः

Extent १ Age

Subject धर्मशास्त्रम् सम्पूर्णम्

CC-0 Dharmartha Trust J&K. An eGangotri-Vaidika Bharata Initiative

नं१०८४-प

सप्तमठम्नायिकाम् (धर्मशास्त्राम्)

पत्रम् १ (सम्पूर्णम्)

CC-0 Dharmartha Trust J&K. An eGangotri-Vaidika Bharata Initiative

श्रीगणेशाय नमः ॥ प्रथमे पश्चिमाम्नाये शारदामठ उच्यते कीटवारः संप्रदायस्तस्य तीर्थाश्रमे पदे १ द्वा
रकाख्यं तु तत्क्षेत्रं स्याद्देवः सिद्धेश्वरो भवेत् भद्रकाली तु देवी स्यादाचार्यो विश्वरूपकः २ गोमतीतीर्थ
ममलं ब्रह्मचारी स्वरूपकः सामवेदस्य वक्ता च तत्र धर्मं समाचरेत् ३ द्वितीयस्तु पूर्वाम्नाये भोगव
र्द्धनमठः स्मृतः भोगवारः संप्रदायो वनारण्यपदे तथा ४ पुरुषोत्तमाख्यं क्षेत्रं जगन्नाथोस्य देवता
विमलाख्या तु देवी स्यादाचार्यः पद्मपादकः ५ तीर्थं महोदधिः प्रोक्तं ब्रह्मचारी प्रकाशकः ऋगाह्व
यस्तस्य वेदस्तत्र धर्मं समाचरेत् ६ तृतीयस्तूत्तराम्नाये ज्योतिर्षोस्तु मठो भवेत् आनंदवारो विज्ञे
यः संप्रदायोस्य सिद्धिकृत् ७ पदानि तस्य ख्यातानि गिरिपर्वतसागराः वदरिकाश्रमं क्षेत्रं ना
रायणोस्य देवता ८ देवी पुण्यागिरी ज्ञेया तोटकाचार्य उच्यते तीर्थमलखनंदाख्यं नंदाख्यो ब्र
ह्मचारी भवेत् ९ तस्य वेदोप्यथर्वाख्यस्तत्र धर्मं समाचरेत् चतुर्थस्तु दक्षिणाम्नाये शृंगेरी तु म
ठः स्मृतः १० भूरिवाराह्वयस्तस्य संप्रदायो महोत्तमः पदानि त्रीणि ख्यातानि सरस्वती भारती पु
री ११ रामेश्वराह्वयं क्षेत्रमादिवाराहो देवता कामाख्या तस्य देवी स्यात् सर्वकामफलप्रदा १२ पृ
थ्वीधराह्वयाचार्यस्तुंगभद्रेति तीर्थकं चैतन्याख्यो ब्रह्मचारी यजुर्वेदस्य पाठकः १३ उक्ताश्चत्वार
आम्नाया यतीनां तु पृथक् पृथक् अयोऽहं शेषं गोणा यते पिज्ञानेन सिद्धिदा १४ पंचमेतूर्ध्वा

CC-0 Dharmartha Trust J&K. An eGangotri-Vaidika Bharata Initiative

३

म्नायाख्यो सुमेरु मठउत्तमः संप्रदायोस्य काशीस्यात् पदे ज्ञानाविधंस्मृतं १५ कैलासः क्षेत्रमित्युक्तं
देवतास्य निरंजनं देवीमायातथाचार्य ईश्वरः परिकीर्तितः १६ तीर्थमानसरमोक्षे त्रैलोक्यकरणं
महत् तत्र संन्हारमार्गेण सन्यासमद्गमाश्रये १७ षष्ठेत्वात्मनि चाम्नाये परमात्मामठोमहान् स
तो घसंप्रदायः पदं योगमनुस्मरेत् १८ नभः सरोवरं क्षेत्रं परमहंसोस्य देवता देवीस्यान्मानसिमा
याह्याचार्यश्चेतनाह्वयः १९ त्रिकुटीतीर्थमत्रैक्ये सर्वपुण्यप्रदायके भवपाशविनाशाय सन्या
सं तत्र चाश्रयेत् २० सप्तमे निष्कलाम्नाये सहस्रारकजे मठः संप्रदायो सतत्स्तत्र श्रीगुरोः पा
दुके पदे २१ तत्रानुभवक्षेत्रे स्यात् हिंस्वरूपोस्य देवता देवी चैतन्यशक्तिः स्यादाचार्यः सद्गुरुस्म
तः २२ सच्छास्त्रश्रवणं तीर्थं जन्मोत्पत्ति विनाशके हर्णानंदक्रमेणैव सन्यासं तत्र चा श्र
येत् २३ पूर्वाचार्यकृता चैषा सप्ताम्नायप्रणालिका सप्ताम्नायास्तु यो वेत्ति स योगीशः प्रोच्यते २४
इति श्रीमच्छंकराचार्यविरचितं सप्तमठाम्नायिकं संपूर्णं ॥ वाराणस्यां पुरारिः परमकरुणया
मुक्तिदो विश्वभक्तं गंगायामर्द्धदेहं हरिहर रिसेकविं ग्राहकर्णे किलेदं नेयं गंगा न काशी त्वमपि
च न हरिर्मुक्तिदानेव चाहं सर्वं चैतन्यमात्रं जगदिदमखिलं स्वस्वभावं विहिदिवर्ते २८ ॥ ॥
॥ ॥ ॥ ॥ ॥ ॥ ॥

CC-0 Dharmartha Trust J&K. An eGangotri-Vaidika Bharata Initiative